श्रीॐ नमो भगवते आर्यामोघपाशावलोकितेश्वराय बोधिसत्त्वाय महाकारुणिकाय ॥ एवं मया श्रुतम् एकस्मिन् स-
मये भगवान् पोतलके पर्वते विहरति स्म ॥ आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य भवने अनेकसालतमालचम्पका-
शोकातिमुक्तकनानारत्नसमलंकृते महता भिक्षुसंघेन सार्धम् अष्टादशभिर्भिक्षुसहस्रैरनेकैश्च बोधिस-
त्त्वकोटिनियुतशतसहस्रैः ॥ अनेकैश्च शुद्धावासकायिकैर्देवपुत्रकोटिनियुतशतसहस्रैः ईश्वरमहेश्वरपुत्रप्रमुखैः ब्र-
ह्मसहाम्पतिब्रह्मकायिकानेकदेवपुत्राभिवृतो धर्म्मं देशयति स्म ॥ अथ खल्वार्यावलोकितेश्वरो बोधिसत्त्वो महास

स्वस्थच्छायामसनो देवानां समुत्पन्नानां संस्कृत्वा दद्मि भोजानुमदसं पृथिवीप्रदेशे प्रत्यायन भगवांस्तेनोपसंक्रमिष्यति आयुःप्रह
स्मिन्नवदन्न्यत्वा भगवंन्तं ममकदवोवन् सुखिमम भगवन्नमाघ्याय भगवाङ्ज्ञानमद्दयंप मयायापूर्वमकन्नेवमिमक्लेषवि ८
ताविकमायां स्वाधमंकोत्स्वाकेंद्रवाजस्य नन्यगदस्य सकाशाद्गृहीत्वा यन्नम मनवानीश्वरमकवरं दैवपुत्रप्रमुखानि वि १
द्दानिधुत्वावासकायिकदेवपुत्रप्रमुखानि जनकदेवपुत्रसमसहस्राणि समादापितानि सुलुतवायांसस्यकंयायौ
संभाषमानपूर्वप्रमुखानि वमयानि वमयादसहस्राणि सम्प्रतिसम्पन्नानि ॥ यस्मिंश्च पुनर्भगवन् पृथि

वीप्रदेशे ऽयं सर्वाध्याय समुदयंप्रवर्षमविदिमनयां ॥ भगवंस्तस्मिन् पृथिवीप्रदेशे ऽहमवनमस्कृत्वा स्वकायिकाप्रमुखानि दग
देवपुत्रसहस्राणि स्वकायवर्णगुप्तरायायास्यानि वैन्यसंमतो भगवन् सर्वपृथिवीप्रदेशो भविष्यति । यत्रेदमेवोप्यायास्याद
दयंप्रविविष्यानिषु लेक्तपुष्पकोटिनियुतशतसहस्रवर्णायितकुशलमुलानि भगवन् सलोकविषये ॥ यद्इदं मदीयममाघ्य
यागदयंश्रुतप्रकाशिता ॥ कस्मिंश् भगवन् कौलिषकाललोक्यान्ता सर्वपापादः पाप धर्मसमाचार आर्यापवादकः सद्धर्मप्रतिक्षे
पकः सुवीवीपवायनः सर्वबुद्धबोधिसत्वाचार्यप्रत्येकबुद्धप्रतिक्षेपकः सर्वेदृष्टिपतितासान्तं गहेत्वा ये ल्यां सम्प्रवर्तमानाय योगतसैः

वज्रहस्तेन त्रकायवास्फोटेन कृत्येवकर्मानि कर्मविषुद्धानियर्स्कयंगहदि नांनिरुवनित्यकाहिकेन स्त्वेरात्माहिके

नवा त्र्याहिकेनवा चातुर्थकेनवा सप्ताहिकेनवा ... भेदेनमा॥ अक्षिशूलेनवा कर्णशूलेनवा नासाशूलेनवा दंतशूलेनवा

जिह्वाशूलेनवा तालुशूलेनवा हृदयशूलेनवा उदरशूलेनवा वस्तिशूलेनवा पार्श्वशूलेनवा कटिशूलेनवा अंगप्रत्यंगशू २

लेनवा गुल्माय हृद्गीशूलेनवा भूतसंविसावा हृद्रक्तपादवेदनेनवा सिवेदनाया वालोहकेविद्रुकुष्ठविचर्चिकाकि

टिभलूताहलिंगमसूरियहगन्दुरविसर्पकाकरोगपसारककिरीटिकोलाविकैलन्येवाकमापकगैः वियवन्धनेकाउनकडनारे

कायां रक्षांनेवा॥ संभुपमाल भगवन्नेकाययीडयावावाद्धिजनीडयावादुःस्वप्नदर्शनेनवा नक्षत्रपविकल्पंगहनि॥ पयेवदानंगहु

नि॥ पापेगकृगुह्यसत्वानां अपुण्याधिमुक्तिकानां॥ यदिरुगवन्नेभ्यस्कृः पविपद्मसत्वावावग्रहमायासच्छेनायियदूदंमदीयम

मायासहृदयंस्थापयामि उक्तहीपांनिवावयियध्वानिनिमिषानिसिवायपियपानियपिवापपानि अनुस्यपांयसत्वानांअव

स्थियंनिअनुसानियं पानिगवनांवासत्वानांकष्टयुटस्थित्वाकष्टायंदास्यंनि॥ ॐ मानियमत्रयंदानिविन्दयियंनिअनु

त्तरकेपनः अनुपनः अनुविकल्पनः अनुसंप्ररवनः अनुविलंगमनः अनुकरणनः निःक्लेशनः समविकानिष्कपनः विवदिनयंवस्कं

धनः।कुलेनयागेनतुञ्जातूर्णिमि सीवपियकथाः।कथांदसम्योदिग्योवुद्गमृत्रहसंसंयुखदर्शनेकलिष्यामि।भूत्यर्थदेसनांवकलिष्य

मि।येषांसं।यावक्तुस्त्कलिलिविमंवागृहृत्स्मयपिष्वंमि।किंवह्नानेन्यान्यत्स्वैर्वुषावाच्यांषांमि।ह्यमिल्यैयनवायवानुरत्यावा

उक्तगृयनेहेतुनावाप्राञ्ज्ञि।मि।त्वानथंक्लगवनूयंद्रिकेनायविस्मा।विकेन्ध्वनस्यानुरूपेवनकर्गुतुद्वसंसिलानन्द्रह्मस।नियाकेष्य ३

मि।नत्रथपिनामन्वगवनेवक्ष्यादेवचुनूषस्यहूनेवाकर्तुंवंवाकरस्तुविकांवासम्राञ्चूष्यायविस्मारिस्थायांवापिपुद्राञ्जुसमानने

कायेनूनिवनस्यवन्दनस्यकर्तुवस्यकस्तु।लिकायायाञ्जवंकेवमि।ग्वेनानाह्मा।कूंहः।यविसस्मष्टिनावागंधनानिकू।मिर्षामि।क्षयेवसुगंध

सुगतावेमेवक्लगवन्निदंमहीयममायायासहृदयंयःकश्चितुग्रगृह्यधार्ययाः।पेयातां।यावत्मायासोडेनादिपुरुषेयेन्निषांक्लगवनूरवंकुका

मत्वानांमत्रवेकुसलहनुरूविष्यमि।यवयवो।रत्स्यंन।कृतमत्राविरहिनास्परविषम्निसीलसमाधिप्रज्ञापुनयसंतानगंधनामि

तस्मागंधिकेमेवकावोमि।।यःकश्चिद्भगवन्कुलपुत्रोवाकुलदुहिताबामिक्षुर्वाभिक्षुनीउयासकोवाउयासिकाबाअन्यावाकश्वी

सत्वकूमोसायासहृदयमुद्दिश्यशुक्लाह्न्याभुपवासंकृत्वीसुपरवावानमायायासहृदयेंमहायनस्याववरीरुनस्यक्लगवनदृष्ट

वधर्मविसिहरिवनुसंसान्वनिकांकुकथाः।कनमेविसिहिः।यदुनयागमन्यास्थकायेनाक्र्याणन।उत्याभ्रावायस्योगमःकर्मवेसेनहिरं

तसमं वायास्यन्ति । सिञ्च्यमनोज्ञ गुन स्मगात्र स्म भविष्यन्ति । स्वद्ध जन प्रिय स्म भविष्यन्ति । सुर्पिं डियः सूर्यप्रन्ति लं लस्मा स्य भविष्यन्ति
ढल्या ल्लें वासायथं न वैरावित्र सामान्ति । सुग्नि नान दह्यते । नोदकेन क्लिद्यन्ते न वायुना सर्व क्लिमनसा स्यय हर्दें । कर्मी काघास्यस्की
तल भविष्यन्ति । मासानि नोदकलयं भविष्यन्ति । नवा न दह्यिर्ल भविष्यन्ति । सर्व वाम नमो प्रयासहृदये नल स्मादकं वाय विरुध्यदि ४
स्मिदिगं यरूर्द्व ऊ त्रयस्य वन्मा दान वाः । सेर्वी उद वाउ थय सिर्षान्ति । न चौरा दावा स्रो आय हं कुस कुवं न्ति । सर्व मन्त्रा नां व प्रियाल वि
ष्यन्ति । मन सूाप स्य मन कलयं वा स्यमल भविष्यन्ति । उत्पल्नं वास्य सकलयं मा धूं यम समया स्यन्ति ॥ नवा स्याम नुष्यालयं भविष्यन्ति नवका

लोदलयं नवस्त्रा कि नीलयं न स्मृत्यन्ति त्रा स्त्रो । मायल्ले साल भविष्यन्ति । नाग्निना नदह्येते स्म न विषे स्मा कालं करिष्यन्ति । देव मा वाल्यस
नवस निनं न का व व मा गुप्त ये स्मा स्यन्ति । यत्र यत्र पय त्याश्वक्र नक्रा विवहि नम्भ भविष्यन्ति । सर्वे कन्तु ग्रस्तु रिभायेऊ दूम ति सन्ति
अनुसंसा न स्यत्रन्ति कां क्लि न स्याः । सुपवा न मैत्रु धर्मा न प्रादि न स्याश । कल पान हे मतश्चा काले सूर्या व सा कि मभ्य वो वा धि सत्यो मल सत्वो
क्लिन्नु यन संपु भूष्वं दर्हिनं दास्यन्ति । सुरन न कालं करिष्यन्ति । न वान दह्यिर्ल भविष्यन्ति । नशस्त्र क्लिद्येयं न घाद क्लिऊयं नोच्चान प्रसावे नम
व नृदुःख संके भविष्यन्ति । सुप्त स्थि न स्प्लंनि भविष्यन्ति । नाथो मुख कालं भविष्यन्ति । मरन काले सूर्य यत्रन्ति ताभ्यां भविष्यन्ति । यत्र

वा मायुष्कृत्यप्रणिधिस्तोत्रपठं करिष्यन्ति । अपि च हि सम्यक् करिष्यन्ति । कस्मादस्मिन्दिने दिने त्रिरनुवाचानुपालितवर्द्धे यदि कथ्यः । अथ
मान्सय सत्त्वं दुष्कृतं कृतवन्तः स्मृत्वन सत्त्वकर्त्तव्यं बोधिहितविंशगाथिनाम्ना भगवन्तः ॥ अयं वा मोचयामि सहदयो धर्मपर्यायः सर्वसत्त्वानां
वत्सावत्सं ज्ञात्वा करवाणि ॥ सत्त्वानामर्थकरस्तेन तु बुद्धबोधिः प्राप्यते बोधिसत्त्वानां भगवानां वगच्छति । बोधिसूत्रं प्रज्ञा सत्त्वं बन्ध ७
उपायः । प्रमोदो धर्मैः हि सत्त्वानामर्थकरं वशं नैव प्राप्यते भवं सम्यग् वदन्नानुज्ञानि यथा न प्रायच्छति दर्शनं तथागतस्य स्तुतं च कीर्त्तयि
येन्नवस्तूनां यविधमर्थायवहितायसत्त्वायजन्म अयं वा पापकारिषं ॥ ॥ अथ खलु भगवानार्यावलोकितेश्वरं बोधिसत्त्वं

महासत्त्वमेतदवोचत् ॥ साधु त्वं शुद्धसत्त्व यस्त्वमनेकानां तेऽमये । अनुमोदितं तथागतैर्यस्मिन्काले यस्मिंस्समये बोधिसत्त्वाय नि
कायिकवाचिकं करिष्यसि ॥ अथ खल्वार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽनिमिषनयनः कृत्वा भगवन्तमेतदवोचत् ॥ स्तुतं भ
गवन् सर्वबोधिसत्त्वनमस्कृतमिदं विमलसुखमण्डलं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हि
ताय सुखाय ॥ ॥ नमस्त्वनुत्तरप्रणिधिचित्तेभ्यः सर्वबोधिसत्त्वेभ्यः । नमः प्रत्येकबुद्धार्यश्रावकसंघेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः
नमः सम्यग्गतानां । नमः सम्यक्प्रतिपन्नानां । नमः सार्वदर्शिकृताय महादानपतये । नमः आर्यमैत्रेयप्रमुखेभ्यो महाबोधिसत्त्वसंघे

ताः नमः सुप्रतिष्ठितगुणरत्नराजप्रभुतेभ्यः सर्वतथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यः भगवतः नमः सुवर्णविमलप्रभाविनेदिमेघ
स्वराजाय तथागताय नमः सिंहविक्रीडितराजाय तथागताय नमः आर्यामितकाय तथागताय नमः सुप्रतिष्ठितगुणमणिकू
टराजाय तथागताय नमः समन्तरश्मिकेतुराजाय तथागताय नमो विपश्यिने तथागताय नमः शिखिने तथागताय ८
नमो विश्वभुवे तथागताय नमः क्रकुच्छन्दाय तथागताय नमः कनकमुनये तथागताय काश्यपाय तथागताय नमः शा
क्यमुनये तथागतायार्हते सम्यक्संबुद्धाय॥ तद्यथा॥ ॐ मुने मुने महामुनये स्वाहा॥ ॐ सम्भव सम महासम रक्ष रक्ष मां सर्व

सत्वानां च सर्वपापं प्रशमन स्वाहा॥ नमः सुपरिकीर्तितनामश्रीराजाय तथागताय नमः समन्तावभासविजितसंग्रामश्रिये तथा
गताय नमः सूर्यकेतुध्वजरश्मिये तथागताय नमो बलपराक्रमस्थवराजाय तथागताय नमो बुद्धाय नमो धर्माय नमः संघाय
॥ नमोऽनुविक्रमनागमत्रलतुल्यप्रज्वलितकुसुमाभिसम्बोधिकालगवतः॥ तद्यथा॥ स्त्रीविवर्द्धनि॥ भवविवर्द्धनि॥ गतिविवर्द्धनि॥ स्थितिविवर्द्धनि॥ प्रज्ञावि
वर्द्धनि॥ प्रतिभानवर्द्धनि॥ ध्यानवर्द्धनि॥ समाधिवर्द्धनि॥ सर्वबोधिपक्षधर्मविवर्द्धनि॥ सकलबुद्धधर्मपरिपूरणीये स्वाहा॥ नमः सर्व
बुद्धायै नमः आर्यावलोकितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय॥ नमो महास्थामप्राप्ताय बोधिसत्वाय महासत्वा

यमकः कारुणिककाय॥ तत्रा नमस्कृत्या ह्रदमार्यावलोकितेश्वरगुणोत्तीममाघवा स्यात् ॐ नामहृदयं तथागतसंमुखस्यापि कमहृद्यो
द्विषत्सेपह्रिमिदानीमावर्त्रयिष्यामि स्वंतु मम तत्रयः सर्वकार्याणि सर्वकरयस्या मम सर्वसत्वानां च रक्षां कुर्वंतु॥ तद्यथा॥ ॐ धर धर धिरि धिरि धु
धु धुरु भर भर भिरि भिरि भुरु भुरु महाकारुणिक स्वाहा॥ संसाधनमंत्रः॥ ॐ सर सर सिरि सिरि सुरु सुरु बुरु बुरु चिरि चिरि धिरि धिरि यिरि यिरि भिरि भिरि महायक्ष ७
हृदयाय स्वाहा॥ विद्वेषणमंत्रः॥ ॐ कल कल किलि किलि कुलु कुलु महागुह्यसत्वाय स्वाहा॥ दिव्यमासंग्राधनमंत्रः॥ ॐ धुर धुर बाधर बाधिर वोध
वर कल कल किलि किलि कुलु कुलु महायक्षगुह्यसत्वाय स्वाहा॥ तथागतमंत्रः॥ ॐ कलकलु किलि किलि कुलु कुलु महाहृदयमथ्राभ्राय स्वाहा॥ निवेशनमंत्रः॥

ॐ वर वर संवर संवर विवरस्त्रय तर तर तिरि तिरि तुरु तुरु दल दल गिलि गिलि गुलु गुलु त्रह्रा हृदि महाकारुणिक स्वाहा॥ आकर्षणमंत्रः॥ ॐ म
हायक्षगुह्यसिद्ध गध गध रध गिलि गिलि मुरु मुरु रव रव रस रस रख रख रल रल रम रम रल रल र हु र हा र हि र हु र॥ ॐ कालच्छेदन्न गध गधस॥ धिरि धिरि धुरु धुरु
मल मल मव मव रस रस रख रख रय रय रव रव र हु वर वर सिसि सम सम हृदय सप्रमि मधुम सर्वितं हुलल रम पर रस स्त्रम रह गवनत्व मादि कायम वर्त्तु
मकुव रवत्रयं इवार्ताः॥ स्थिसनदर्षि देवगण सर्वविधवचना स्वाहा॥ आर्यासमन्ता नमंत्राय तेकाल वगंधपुष्पधूप यनाकर्षति
स्य मंत्रः॥ ॐ धुरु धुरु धुरु धुरु हुलु हुलु रसान कुमार बलपद्म वासव विश्व धनद वायव्य अग्निऋषि विनायक विनायक वरुण विविधे वगध वरिधे

सिद्धयूलु २ धव २ थव २ घल २ यल २ तव २ हूव २ यव २ सल २ वव २ वलदायक स्वाहा ॥ साधकस्य निवेसन मन्त्रः ॥ ओं समन्ताविला
किविलोकिन लोकधारम हृत्व व त्रिदव नम्भवः सर्व्वगुन समलंकृत भूयनाकिन थव २ मुहू २ सुय २ सुंव २ वक २ मां सर्व्व सत्वानां
सर्व्व भयेभ्यः सर्व्वोपद्रवेभ्यः सर्व्वोपसर्ग्गेभ्यः सर्व्व व्याधिभ्यः सर्व्व विषेभ्यः सर्व्व दुःखेभ्यः प्रवंवंधन मादन जज्ञानां जनस्मनां स्मृद्धकवि ८
समसमुद्रयविभावक स्वाहा ॥ ओं कमल २ किलि किलि २ कुलु कुलु २ वस २ विविवि २ ववु २ हूं हूं २ ढियवलवाथं गव ढुवाय सत्यसंप्रकाशक दम २ दम २
समर समस २ थम २ महाकारुनिक महाकमाधकात विषमनाय घ्या वमिनाय लियूरु कमल २ मिलि मिलि २ मुलु मुलु २ ठठ २ ०० २ टि टि २ हूं हूं २

हूं हूं २ प्रनयवर्म्म कृनयसिकव प्रश्मादि महाकारुनिक हूं श्व वमद्रव वमहा हूं द हूं गगनासंलंकृता फट २ किलि किलि २ कुलु कुलु २ धव धव २ हूव २ व
व हू २ व २ कव २ फट ट २ किलि टि २ कुरु दुर २ मट २ महा विशुद्धक्षियनिवासिन महाकारुनिक ॥ सप्तरूप विवास मन्त्रः ॥ ओं नय जायवी नवन्न
सुकूट मालाधर सर्व्व द्विति सिद्ध कवध मुकुट महाव्दके सतां संकृत कवन व्यानसमाधि विभाव प्रकम्य बहू सत्वसंत मियसिया
क सर्व्व कर्म्मावरन विश्मधक सर्व्व रोगानयविपूरक । सर्व्व व्याधि प्रसमावक । सर्व्व सत्वासाय विपूरक सर्व्व सत्व समासीनन कवन मोमेलु स्वाहा ॥
ओं माध्याय स्वाहा ॥ ओं माप्रथासाय स्वाहा ॥ ओं हृजिनाय स्वाहा ॥ ओं पवाहिनाय स्वाहा ॥ ओं मिनासाय स्वाहा ॥ ओं मिसाकगुनाय स्वाहा ॥ मारस

ष्टप्रमर्दनाय स्वाहा ॥ सुरूपप्रदाय स्वाहा ॥ जयाय स्वाहा ॥ विजयाय स्वाहा ॥ जयविजयाय स्वाहा ॥ वज्रधराय स्वाहा ॥ वज्रदाय स्वाहा ॥ सूक्ष्म-
लप्रभूप्रमर्दनाय स्वाहा ॥ ॐ दं वेमे कर्मक्रुनमाहुं जः स्वाहा ॥ हृदयमंत्र ॥ ॐ वज्र हूं फट् स्वाहा ॥ ॐ जय हूं फट् स्वाहा ॥ ॐ हृ ह्रीं हूं फट् स्वा-
हा ॥ ॐ हृदयाय स्वाहा ॥ ॐ ह्रीं स्त्रीं नामविजयाय माधयासम्प्रनिदहदह्रीः हूं फट् ॥ उपहृदयमंत्र ॥ ॐ वज्रमणिय स्वाहा ॥ ॐ त्रां त्रां त्रिक स्वाहा १
ॐ वज्र स्वाहा ॥ ॐ त्रा त्रा त्रिक ह्रीः जीः हूं फट् स्वाहा ॥ नियतानियतपदवदनीया ॥ गुरुमुखेभगवन्कर्माणि सेवद् दः जयं कुरु स्वाहा ॥ ॐ
धर्मरत्नाय स्वाहा ॥ ॐ बुद्धधर्मसंघाय स्वाहा ॥ यः अनेन हृदयमंत्रस्य कर्माणि भवंति । त्रिकालेयम् वानेनत्वानि कर्माणि शिमायत्ते

सर्वकर्मावरणविशुद्धिं च करोति । अनेन भूपनिसीमावन्धः कर्तव्यः । अनेन सर्षपविद्धिश्चिकित्सकायैः सर्वकर्मावरणविशुद्धिं च करोति । सर्वव्याधिशु
द्धं समुद्धर्तं वाय विजयधारण्या कोटिर्हृदं नीत्वाक्षतकर्म ॥ उदकं गुलेन यत्नवशादकं विघ्नानाशनकृत्कियाउदकेन वा वस्तुना
हस्वनक्षत्रकं कर्तुं वक्ष्यन्ति तथा ॥ दं नयुल कल्पीवदं नका लूहि मावंध्यंपवं गिक्रमात्रमकविंसजिवावान्यविजयस्वकुगृहदिग्वलस्कत्
वत्वीयकदिग्सांनिमायकच्छंसीमावच्छेदयानिर्मविकक्तमत्यकनवाकस्मादकेनवामर्वग्रहदुष्टपंवगिकस्मात्रकं सर्वकारणसुरुमन्तुलकं मर्पकोट
लकसाहस्त्रिंगमलमत्रहरेयुमघ्रयिमालोकुनांवज्रममाकामसंवधामासादकंमनुयह्दकं वा सर्वकालिकलहविवादनाशयानिशुद्धकंपविजय

[illegible] पूर्णकलसं स्थापयित्वा [illegible]
[illegible] सर्वसत्वानां [illegible] ॥ [illegible]
[illegible] सर्वानि [illegible] १०
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible] ARCHIVES २४९७

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ११

[illegible] नाम समाधिः प्रतिलब्धः [illegible] ॥ ॥ इदमवोचद्भगवानात्तम-

नास्ते च [illegible] शुद्धावासकायिकाश्च देवपुत्राः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भा-

षितमभ्यनन्दन्निति ॥ ॥ इति [illegible] नाम हृदयं महायानसूत्रं समाप्तं ॥ ॐ ॥ ये धर्म्मा इत्यादि ॥ ॐ ॥

[illegible]

[illegible]

आशा सफू कुथि
2897
ASHA ARCHIVES